Pandey

निघण्टु (?)

DPN 5636

Title : NIGHANTU (?)

Run. No. 6327

Cat. No. DE37 [II-362]

Micro. No.

Subject

Religion : Hindu / Bauddha

Language : Skt. ✓ / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 31x4

Folios 20

Lines (in a page) 4 or 5

Compl. / Incompl. ✓

missing - 1-14, 21, 22, 24, 26, 27, 30, 38, 39, 41, 47

Chapt. / act /

Author / translator

Scribe / donor

Date: NS / SS / VS / KS

Ruler / place

Script : New. ✓ / Dev. ✓ / Bhuj. / Ran. / Mixed

Illus. :

Material : palmleaf / paper ✓ / thyasaphu /

Condition : fine ✓ / damaged ✓ by worms, rats, water /

Beginning, colophon, post-colophon :

centimeter 5 10 15 20

॥ १० ॥ अमेहोणकद्दमेवेकप्पइ सेव विसेघत ॥ दुण्णायस्साभिवाहस्सादवसत्व [illegible] ॥ निंतः ॥ यिसाव [illegible] न्न थोशुलयनउरगमभ [illegible]

[illegible] स्सा भन स्सुतः ॥ सत्वाथायं एकादसम ॥ १० ॥ ऊर्द्धं यवचयं प्रोक्तं मंगलस्य त [illegible] यावलेः ॥ प्रमाणस्सा लिहाचायेवाकिसाप्प विसारादेः हम्मों [illegible]

[illegible] चदरुन्नरयासुतः ॥ चतरूम्मवि स्सातउसेवेमालमाहरिः अर्द्ध [illegible] मनहीनसुन्नविअथरंगमः सक्षिप्तस्सननहमेनहीनस्सा [illegible]

[illegible] नवप्रमाणनपरिणाहं विनि र्दिसेमाउन्नमानांवमथ्यानांहीनानां [illegible] विवुवाउिनांअर्द्धसमभरू [illegible] द्धंदे [illegible] नतिर्दिसरु ॥ [illegible]

[illegible] मसत्रुम्मं च विचकुणः ॥ पंचदसमभर्म णस्स ऊं दप्पयपरिकीर्तितः ॥ [illegible] दउलवत्रो [illegible] नमाप्पस्सकीर्तितो [illegible] व [illegible] काटिं विवम [illegible]

5

0

centimeter 5

10

15

20

25

30

...स्त्रात्री श्रायः नवमः ॥ ० ॥ वाजिम रीरे युसत्रासत्र निवेदनी ॥ वाजिनः प्रतो जिस्विवर्गं प्रवीम्यहं स्वर्गसः ॥ सान्निध्या योषिद्वीकाद
...वतायप्र रागारुणी ॥ विवश्रायेधीयरि कीर्त्तिता ॥ स्वद्दस्तरिक्तिसंकासास मेघा विववारुणी ॥ क्लीदीनावत्रायथायरूषा ॥ विवकीर्त्तिता ॥ याद्य
...स्त्रयीवारुणी यावकीर्त्तिता ॥ विस्त्रःप्र ग्रह्णायावायथावामृतप्रदाढयाश्रायः दसमः । ० ॥ प्रभिनानात्तवोगत्वोवाद्दानां शात्रसंनवः ॥
...ःमेनिर्द्दिक्षसेनामृन्त निवेदन ॥ मृनस ःरूरूनेत्वक्षिप्राणमार्गनस्त्रूयसमस्ता ॥ वाजिगवज्रविपरीतस्वरूसितः ॥ सनगा ॥ त्रानवेद्धाली
...स्वद्धद्ययो ॥ मित्रावा ॥ प्रिंऊयं ॥ विवकल्याणवनि यछतिश्रनिश्चाविवगवे रसवर्मेतस्वीयकं ॥ यघामाप्रम द्विस्रीगत्र श्रीरगामोमया ॥ गत्राश...

द्विवर्षस्या स्वक्रा ॥ स्विवायढऊम्मनः ॥ वयो थायत्रयोदस मः ० । दसा दसककमध्यानां जीवितं परिकीर्त्तितां ॥ प्रवरं वाजिनामेतत्रस्वणास्ऊताय्परांगां ॥ वासराः सप्रति
द्विासवधीणां ॥ वतघात्रयाः दशाप्रमानं वाहानांसा ॥ र लिाह्नात्रेणको निर्तिं ॥ प्रघमेप्रघमा ॥ विवद्धितीयावद्धितीयकं ॥ एवंप्रमाणेनदसानव द्धेत्रे परलप्रदा ॥ प्रया
नादालनाढं उप्रघमा त्रित्रमृच्यानाललाटा मप्रकः यावद्धितीयं समदादत्तं ॥ ग्रीवाक्षु ॥ वाविधिक्षिप्तत्रितीयपरिकीर्त्तितः ॥ उराजस्त्तत्व्यासवर्णरूदकाक संतघा ॥
वउर्धविहितं दोत्रैयं च मे चासनेनवेशा ॥ वदंतिसर्धव कर्तिसप्रमस्त्रियदाढतां ॥ सूरूकोवाक्षमंशेत्रऊ पाचनवमस्मृतं ॥ कूर्वं सविंशद्दर सिवदसमं यरिकीर्त्तितां ॥ एवंवु
द्धालिस्वरूसमध्यकुद्समस्फलमादिसेश ॥ केत्रसाम्यद सायाहवाया ॥ क्षानयवरायनाः ॥ कनसवर्त्रिनोत्रस्तसतद्यासंगा ॥ वितस्य चासर्वकालपरलं द्दस्व द...

धर्मरत्न बज्राचार्य गुरुत श्री महाबिहार II-362

इर्षिकाः दृसक्ष्वेताः यस्य हह्दृसः ० ॥ प्रस्थानां तु मदे साश्वप्रवक्ष्याम्यतः पूर्वमेसः ॥ उत्तमानामश्वमध्यानां हीनानां यत्र संभवः ॥ उत्तमा मध्यिका प्रोक्ता तथा परा

किकाल्यश्चिदायवाहाः प्रस्थाना यववीर्तिताः ॥ उरजा नाश्वकी राज्ञत स्वमा मादं जश्वयो दक्कुजा सेवा श्वेवन धासार श्वताश्व ये संतलाश्वाकुला श्वेवजदद्द सा

ङ्कवाश्वाया श्रवमाश्चङ्गनेः साङ्घेयत्र प्रागदक्षिणा ह वाहलदीर्घविनग्रीवाहू स्वकल्लोमहाजवाः महाकायामाहार क्षानि स्रामामाधिकास्मृताः अस्त तविनतांत

धानि ग्रामसवप्रसंस्मृताः पीनेन कटिदेसेन सत्वराश्वन वंसितो अश्वा याम सदाः सूराः संग्रामे सेव पूजिताः अपि सश्च हृत गाश्च निवृत्तं निमादिनं यारमि कामाजिका

नाकेकाणा किं विहूरकाः स्थूला स्वघमरीराश्वप्रस्थाना दीर्घपृष्ठकाः ॥ कं काणदेशजानानां प्रस्थानानां वाजिनां ॥ ताजिकोमहत्संवक्षा वाहल्येन विनिर्दिसेत् ॥ स्वदेनार्द

हतीक्षुस्वयमालेन च मध्यमः ॥ उरजा नसमुद्दिष्टं की रस्थूलोमनां गतः ॥ अतिस्थूलो अतिकक्षश्व ह्रस्वग्रीवतरश्व या ॥ तरस्कक्ष कीर्तितो वाजी स्थूलजंघ मरत्वस्वयः ॥ प

कालकार दिंहरत्न विश्वाट विके हयः ॥ सन्धुलेव प्रमा लोन केवलमेवमम ॥ सिंधूदेसोद्भवो वाजी प्रस्थानस्या सकारकः ॥ आननं तं नवदीर्घंच तस्य पृष्ठं प्रकीर्तिता ॥ परिम

उलादिहस्वता हूकल्म स्वाहयाः ॥ टकादासाद्वाह स्थूतधामारस्वतश्वाया लश्वकास्लोजवश्चिवस्र स्थालः परिकीर्तितः ॥ संतलः क्षिप्रजानश्वजदुजश्वा स्थूलोयम ः

वर्तलश्वातिहस्व पारद्भुणः पारिकीर्तितः ॥ दाक्षिणा लोत्तवेकं डोजयप्यः सर्ववाजिनां ॥ जवहीनो न खेदस्पृष्टप्रदेस सम्भूवः ॥ वाजिवन्धेन राणां तुदमं विद्यावि

वक्षणः ॥ जन्मादिमाध्यायपंचदसः ० ॥ प्रस्थानम धहीनानो दसकालवलं प्रतिवाजिनामयायागाय दध्यमात्रा निवीयता ॥ यक्कल्पलायलिमोघः सप्रा [illegible]

कीर्त्तितः ॥ माषिकाद्यमनिःकर्षात्तेषु द्वरुर्निःपलं नवे
पञ्चन्ता समताघिकद्वाद्धाणस्यकीर्त्तिता संख्याप्रमाण
१६ एकस्मिन्निवदातव्यं दिनेवा दस्य निस्संसा अविनश्चो ।
दायाभ्रहः ॥ वनकाज्ञिवमासाञ्चायवान्यधीरुप्यमघा
वापकखलवलमस्यद्वान अमालेनमनिलिन लवणेनत

याचतः पलस्यान्तद्रवप्रस्थयोऽस्मनिः पालेनवरुप्रस्थेस्त्रघा ॥ विवश्चाढकः परिकीर्त्तितः ॥ सतद्भ
स्नानकोविदैः ॥ सप्तद्रव्यस्य मात्रे घाद्दव स्याद्धिगुणान्तावदु ॥ मूलादीनां मद्यकानां द्रवरल्योविविस्मृतः ॥
स्याविसूर्लमाढकानां वरुन्तयं ॥ पायेन श्राढकोद्दय समिद्धान्तोऽजनतघा ॥ मालेश्व तण्डुलानां उग्रं द्विवप्र
।घवाद्दैनप्रयोक्तथा देस्मान्नि चखादानामक्रप्रस्थादेस्त्र ॥ या ॥ या ॥ घावाञ्जीनां मक्ष्याद्जलोऽजनो ॥ त्रयप्रस्थ हश्च
।खिवचा ॥ मा ॥ मामक्षुमसमाद्दयान्त्राजनायववाजिनां ॥ मपर्थिमस्थापियण्णा घैप्रस्थं दद्याद्धिवरुणः ॥ मद्गुनेःकं

उवंचायिंहानितस्यताघेवच ॥ सर्कारा ॥ विवसंरक्षत
प्रतिपानसचरायाश्वप्रस्थमेकंप्रदापायरु ॥ भूयं
संप्रदायपथ्यरु ॥ आढकंवकषायस्यदद्याद्वृद्धिमताः
वद्भिरुरस्तितनवेरु ॥ कसायप्रतियानानांक्षोस्ये
यायतदलप्रस्थायथारुद्धिगुणेनरु ॥ त्ताक्षितस्यान्न

घामस्यंडिकामयिाहानितस्यप्रमाणेनदायधेमतिमांसिषकु ॥ श्रर्द्धप्रस्थंरुतिलस्यपलान्यष्टौ गुडस्य च ।
वलवणं ॥ विवपिंडिकां ॥ विवद्धिमाश्चवरुष्टलहृतंदद्यात् ॥ हवायानन्ताजन्तो ॥ पलानि दस्कवान्कस्यानिरुह
वरुः ॥ तावप्रमाणं क्षीरं च क्षीरवान्सो प्रकीर्त्तितं ॥ मेहप्रस्थप्रदातव्यो निरूहस्य च वाजिनां ॥ श्वसंगंकारयेत्ता
परिकीर्त्तितो ॥ प्रतियानाश्वलं सूषद्धिगुणं ॥ विवदापयेत् ॥ श्रक्षीढकश्चदातव्यो रससस्यो कोविदरुणेन ॥ ये
यानायसरापस्थप्रकीर्त्तितः ॥ पाचायेतंदलप्रस्थंतदलोस्वाकमर्णि ॥ यवागूमंडकल्पेन दद्यात् ॥

5
0
centimeter 5 10 15 20 25 30

ह्वा प्रस्थो समकुकाभ्यं तस्मन्पाने खुदा यये ॥ गुडस्य तयलानन्त्रो ग्राहकौ त्वेववालिनः ॥ हरोरसससंदद्योह्याणार्घं च स्यखोदकः ॥ प्रतियाने पल
णां सूरयासह ॥ मुदस्य शङ्करवक्षिवनस्यार्घ यरिकी र्त्तितः ॥ नेदनीयेवनीकूलवयाद्दानं संप्रयोगाय २ ॥ कर्णायाप्रस्थेण ॥ ब्राह्मणतनाहतसम्मितः ॥ स्तरा
१२ विरेको दातथ मर्दगुडगुडवस्य वा ॥ अथवस्यपाल दं यादिसानकस्यैमासकः ॥ नत्रप्रदायवयेश्वस्यकर्ष मिकप्रदाय यर २ ॥ कृष्णकृष्णत्रयः कर्षौ धृत
कर्षं स्यामोरतः ॥ अनिर्दिष्टकया सम्युपादसे ध प्र कीर्त्तितः ॥ निर्दिसेष प्रमाणानां द्रव्याणां पलमादिसेत् ॥ रुधिरस्याढको देयः प्राणार्घं यत्र दृश्यते
विंसति विसुणो वित्तवारिजानां प्रकीर्त्तिता ॥ अत्र यानां तथा संति स तगांगलवारिणा ॥ मांसानां कारयेत्सम्यक् पलसंख्या मिमां बुधः ॥ रसके तोऽनां

वाजिनां हितकाम्यया ॥ सिसुमारादागो ॥ धनगो मसमूककर्कटाः ॥ सखकसयसस्त्याद्या कीर्त्तिता जलसंभवा ॥ गवयोगजो ह्रस्वी शूकरो महिषो रुरुः ॥ अ
न्नेयाविहिता सेनाय वान्येश्रूपवासिनः ॥ कुलं सारसेढी पिञ्जाग सिंहनरज्ञवः ॥ मत्वारेनकनीलाङ्ग दृष्यातो ज्ञाविकितकाः ॥ जांगलाय श्व प्रोक्ताः
यवान्धिषुलवारिणः ॥ ससोतिलपूरने पाय क्षीविवाविकास्मृता ॥ ऊं सृवेतसलिनालकदलीनत्वेवेस्मृतिः ॥ पूर्वाक्ताव ऊर्जलानिम्ना देसानू पऊदाह
तः ॥ कसेरकसमीपिलुकरीरकृमससारेः ॥ खदि तेश्वा यिघेषु कान्तधावकाले युतः ॥ जलहीनस्थली प्रायाद्दासा गांगलउच्यते ॥ मासमरणाद्भिस्या
स्वनरूपामाश्मरणाप्रत्ताः ॥ तसासस प्रयोगेडुम नासामरणास्मृता ॥ पञ्जिणः यसवः ज्ञायिा पिस्याद समममसमाः ॥ वारिजाग्रवः ज्ञियाः

श्वसकृज्ञा॥ आनूया‥रिले स्नल्या किंविने सोलप्
णसमृस्तुताः॥ हृद्या भरणा सद्राः॥ रसवीर्यविपा ।
१८ न्नितः॥ स्नेहे कल्कोय दांगुल्यावन्निता वन्नि चडूत्विशाव
यानकिंचिदरा तेवर॥ मथमोत्र महीना नामथा
श्चिहायानदियमूर्ख दृश्या ततः परं॥ कायवाल्यग्र ।

स्मृतः॥ ततो घसमनावल्या जांगलास्तु गयकिलः॥ अनन्निष्यादिनो हृद्याकाया गेस्त्रा विराप
काश्चात घांसा भरणा मताः॥ कल्काविर्युणाः स्नेहा भिहाकाय स्वतर्गुणाः॥ स्नेहृयाके विकंस्त्रायं मामान्यः यारेन्ना
फ्लोशिपेवनो सहस्रधा सिद्धं विनिर्दिसेत्॥ यएनास्यतघा वृस्त्रीमृहृयाकप्रकीर्त्तितः॥ अत्यंगे मथ्याकस्तू
मेवविनद्राणः॥ वायाणस्त्यं दृश्यानिराय येवसरीरतः॥ वषंजातेत्तवेला यादाद्विपायाद्वि वद्धिदायानामूयः ।
मालंवदृश्या माघाकानी यमी॥ महाकायतघा मूलपयोघा मथमोत्र मा॥ काघयानप्रलेयभृयायस्त्रायि

पितघावंध्व:॥ अग्निर्दिस्वरलीप्रोक्तः लवनेत्वायिसि
ना वंसादली छिन्नस्हा गडूचीतन्त्रिकास्मृता॥ हृष्
यिक्षस्त्र वालकः॥ उरस्तुकोथा प्रदल स्वधागवर्वंह्र ।
दंती प्रोक्तानिकुंभिका॥ एला घीलास्थूना॥ यावाश्र स्व
मारिवागोयीष्टका‥लता लपुः॥ मृद्धीकागोस्तनी॥

ववांद्यघमात्राथायः॥ ॰॥ निघंटु संप्रवक्ष्यामि सर्वसाध्रांलसारतः॥ द्रव्याणां मनवावाबुस्त्रायनमस्त्र कृजाय
वामादृस्यष्ठवासकः परिकीर्त्तितः॥ गृहूविंदृस्मृतमूत्रामपाद्वंसप्रकीर्त्तिता॥ प्रदोघाकलनामावविहि ।
म्रकः॥ परंउकीर्त्तिता॥ विघ्येर्वाता निश्च विसेषतः॥ वृसंदंडीवत्ता गीवनेतघावद्धि यूष्किका॥ मकलोद्वरदला
घावघप्रकीर्त्तिता॥ जघणा चविकाचथाग्निजमोघ्रास्त्रघंकां॥ जिंगीवविकसाचायि मंजिष्ठापरिकीर्त्तिता॥ अनन्ता
द्राक्षाकर्तूरावसघीस्तुताः॥ श्रीवेष्ठकंसदावेष्ठं सरजीमस्लिकीश्रवा॥ कच्छूरातामृयूष्ठीविनादेघि-

श्वत्थः पियालो ङ्केयो ग्रोक्षवद्भुद्धाटः। उडुम्बरश्वयं हेम गोगईनोडकयीतनः॥ यासानन्तेदो विख्यातः मिलानेनोस्मन्तेदकः॥ यामानन्तेदो विख्यातः मिलानेनोऽग
दनीवर्वदाकोस्मरमालसीनसी। राद्वसी विवचगुआववो रथ्थानिवीयता। अग्रयस्त्लो दमंकृष्णा। गन्धायोगन्धा यिप्रकीर्त्तितः। यवानिका तुहूतिका स्वदिरं दन्नवावनोनलद
१२ विवमांसी राहमास्थनागकेसरः। शाकाइदीचस्ववहाश दस्तेजनकः स्मरः॥ सूडालः सूक्तलाश्चिवउश्चटः परिकीर्त्तितः॥ वीजकूटरहहृस्यकीर्त्तितमनिनिः सूराः॥ कलिंगेद्रय
वाद्यं उवसकोवस्सतहकः॥ उटिर्चयः श्वासक्ष्मेलाश्चल लानाटकायरला। अग्रद्वीवस्त्रा शिकास्विवस्त्रचुकः परिकीर्त्तितः॥ युग्मपत्रः कोविदारः द्वीरकः कोकिलाक्षकः॥ मिश्रः सो
लाऊनः प्रोक्त स्वपरलं मरिचं सितं। अतीवलमहायवोसू क्ष्मयचावलीस्मृता॥ समासीवाशुपथ्यविवयालावाद्यान्तदनी। महाद्रुमश्चवजीवस्वादा विवस्वदीस्मृता। अर्कस्य

रविमोनामानिविडंग्यानिविचकूलः॥ वृहरः कांसनः प्रोक्तम्प्रघावोप्यलकस्तुसः॥ करवीरोश्वमारश्च चित्रकोवह्निसंज्ञकः। कोसातकीमहाजालीराजकोसातकीतथा। अपामार्ग
वडुतिस्थानापोपुकाश्चतिस्वरितिः॥ आरग्वधः कृतमा लथा वरिश्व हरं गुलः। मार्जनन्निलकाश्चैव मा भारारो रव्वउद्यात। रक्तमालकरंजश्च प्रकीर्य श्चैव कीर्त्तितः। पूतीप
रंगऊता मुपृतिकाश्चिरवि त्रतः। कपिकुम्भदविश्लुः स्यामा लूरोदिब्रुडुहु। तोमाटलोमषकः प्रोक्तः। तथाविदांसकास्मृताः। हृदकोवस्सकाश्चैवशृङ्गोगिरिमल्लिका। वीज
कोवीजपूरस्यमातुलिंगश्च पूरकः। कदलीकीर्त्तितार नाहरिद्रारात्रिनामिकाः। आक्रूकसीइवंतीचमूषिकामूषिकसिंका। सर्वाङ्गूतिसरनात्रिशृताकालमविका
मपूरविदलावायिग्रहु नाहयश्चिकाः। घस्त्रिकाति रसीन्नूपंह्लीतकंमहयश्चिका। पथ्या कंमश्रकावतिकीर्त्तिता। माषश्च विदिनिः॥ हमवष्टयगन्धा चपद्धु

ताः॥ सकलादन्त्यरिष्टा ककट्काकरोहिणी॥ प्रियंगुफ
कल्गिका॥ अपराजिता समुद्दिष्टा॥ विष्णुवंसक्षकी त्रिंतः॥
२० क्षालोमदामहा॥ मञ्जपली कृष्णसहायययत्यादिलप्व
श्वदृशपली कलसी वावनी तथा॥ वार्त्ताकी वृहती सिंही
मलाकोमललक्ष्मासथ्यष्ठासीरउच्यात॥ यलंकसाय

लिनी श्यामा विष्वक्सेनी वकी त्रिंता॥ यवासो वक्रया स्वस्वद्दृष्टसो वदूरालत्ता॥ स्वेताप्वदू वरद्ध रिपा॥
संखिनी निकला॥ प्रोक्तास ह्लालाचुप्रकारिका॥ उपत्तेस्याद्दसलको डीवकः चूर्ल्सी घर्कः॥ सीतया॥
षिका॥ ह्वी रिका॥ राऊदाव दांतघा॥ वियाघिंवादिनी॥ मालपल्यास्समतिस्याप्नघावा यिष्ठिराकवा॥ वृष्मिपली
मांडकीड्ःपूर्वपेली॥ निदिग्धिका स्पृसी या भ्रीवृहतीकंट्वारिका॥ राठंयिंडी स्तकंसालंघ्वसंमदनंफलं॥ ला
सिग्रश्वकोसिका गुगुलःपूरः॥ मोणाकोदीर्घतृन्नश्वकद्रुद्रुस्विवद्दृवः॥ काकाद्दुस्वरकः फन्गुर्मलयूकेड्

गोक्षुरो वृहती विवसालयश्ली निदिग्धिका॥ पंचमू
लकी त्रिंता॥ मरीच सा च वश्च्याश्च पिप्पलीनाताघेव
संयुक्ता वा रुद्ध्या सत्कण्ठ्यात॥ लवणो कारस्तालीसध्व
पना स्मृता॥ स[illegible]त्रिकृत्समुद्दिष्टा एषा मदनपो
कगोपाल मालाकारवानवराह॥ पृष्णिनामा निदा

लंन्नवेक्रुइ पृथ्वपर्ली समायुतं॥ पंचमूलद्वयं विवेदसमूलमितिस्मृतं॥ सन्निपातोत्तवरोग हृतमत
चापर्ध त्रिकटुकं प्रोक्तं याप्तारव्यपरसनं तथा॥ त्वगेलापत्रसंयोगः त्रिगदश्चवर्गबकः॥ नागकेसर
युते यद्दुणे चूर्द्विः॥ प्रतिसारणे तथा प्रोक्तं वाजिमाश्चविसारदैः॥ अनुवासनविस॥ योनिनिरूहास्थ
वनैः॥ प्राणमागेणय हूर्तं प्रोच्यते सस्वावायुन॥ प्रघमलंतद्विख्यातं तक्र[illegible]॥ कामहर
नीयाङ्कषत्रानि विवक्षणः॥ निघण्ठाध्यायः ०॥ घृष्ठष्ट नंभवश्च मिश्रु रंगानां समासः॥ ७

शालिहोत्रादिभिः पूर्वं यथासम्यक्प्रकीर्त्तितं ॥ आवलम्बुतथा नाड्याद्योमालोवर्धकच्यातांश्चवित्तुःकान्तिकुःश्चिवसरकालप्रकीर्त्तितः ॥ मर्गव्यायो…नतमातिव
मध्यपरान्गानो ॥ व…श्चेनविसोरवो ग्रोष्मो घेषस विम्नघ्राप्राग्रहस्थूलतत्देलस्थाश्चकाटकावद्गितो ॥ विता त्रिलविद्दी । नवमा…
२२ सीचवान्र्वेद्याः क्षकाः …हसंस्मृताः ॥ सीघ्रकेश्चायपित्वा हत्तुवंस्थूडायस दाकार्यात्रिहन्नविश्री लीलालालाख्यायिंडिकासुता ॥ सालाप्रमात्तदीपीचतस्याप्वा
सप्रदायायहु ॥ ह्वोहस्नावश्रुघलस्पामानतेवप्रकीर्त्तितं ॥ तिर्यो…काष्वदंडाश्चपानेश्रस्पादायायद्धहिः ॥ अग्निकार्यन्ततःहोता ह्विजासंत्ताघेवारनाश…होवा
धूल्याहवादिवनतावारूश्रवामयेह ॥ समृखांश्चाय यतान्नुपच्छगवांदिषुडिनाग्रा ॥ रहुद्वयनिवह्वायश्चाल्पामेनसंयूताह ॥ लोहकेनिश्चपत्रालियवल्लस…

दयंच्यराह्वादाययेद्ध्वंः प्रत्नातेनिश्चमाद्यायवा मध्यंदिनतथा ॥ द्विवसस्याक्षमेतागेनोडनस्यत्तवेह्विविः ॥ नस्यपानप्रयोगानांक्षर्थाकृविवकीर्त्तितः ॥ पिप्पल्या
संगावरत्नविश्व…लसतोकया ॥ लवानेःसरया सार्द्धप्रविपानेच्चनागमे ॥ श्वश्छद्दनेश्राविद्योघनविक्षने ॥ ० ॥ सरदिस्याश्चिनमासस्य…काल…
यांश्रुपालिर्य…तेप्राकृकिवालेयासंग्याति मृक्ता ताडंगसस्यातनस्यातायंपानावगाहानः ॥ संतनस्यत्वकर्न्नेयःक्षीरवृभित्रमोविविंः ॥ निम्नमाडल
वांतश्चायवाम…हितास्मृताः ॥ उदकाश्चायियव सारकषिनम्रसामकाःकाथ्यर्थाश्चकयरमृभ्नेवदनंकद्दाराहिनी ॥ उसीरमर्कोनविवप्रियंगु…

5
0
centimeter 5 10 15 20 25 30

१९

पुष्पोलत्रायमाण[...]दसमं च नवे हुवा पतद्दंसांगमि
तासमीनं च प्रवा[...]स्थानं तथाप्यकीर्त्तितं। विज्ञनं
मेवयसंयुतः॥ र[...]क्रयदोहितीयाथांमालासंव।
र्द्धयनईद्याघ्वसंथानगयाताप्रयोनिश्वदलेः।

स्पर्शकोसीभूलासंप्रदायये॥ अथात्र ग्रामनगराणां प्रतिमानं हवाजिनां। चंदनोसीरकाल्कसमाद्रं
तालश्चनिम्बविमीलोताघमह्वानं। दयंभरदिवाघ्यायत्ता ऊनं श्रीरसालिनिः॥ मांसघृ खेर[...]ल्लुवोकिंव
ग्धरह्नयर॥ आद्रिस्थरस्मितोवाह्मकाष्ठिवंशाद्रिकेम्मघा। अभ्रेगात दिनकरे करादीनप्रकर्षे[...]॥ फ्वाता
कायोप्हृतशूयसंयतः। सालाप्रवस्थाविदितां रुद्राणं चिवदापाय॥ प्वर्लेतत्र मणं चिवतघा विवायमद

नं। ०। वसन्ते वा हृयेदाघ्वात्ता ऊनं निवदायाय खा
मिकाद्धोवाहितस्यतां घोषलोप्रविडिगिधमसाकोद्दे
तयिदिवृसंसर्वद्द[...]याय द्धाजिसाप्रविरः। वसन्तयो।
तीवप मेतघ्रानाम[...]रदंकाराय द्विविंशोरयूकंसता
वाल्मोकोदीमूलकं कस्वदीर भाडालादित्तम्रघायी

दूने प्रजितासेघांसपेहताकेवलोयवाः॥ अथाद्याश्च हाघ्रुदात य्थलवनंस्व ल्युमात्रयो॥ प्वासम् ह्याडलेवर
सिद्ववाद्वितिः। प्रतियानं हितं दृक्षं वसेतम दिराधूतं॥ हेम नि सिसिरे विद्वाहवस न्वेस[...]नगमात॥ अ
घणं। ०॥ स्नानं स्त्रायायाघृतैस मंयोश्चेवायाम वर्ज्जनं॥ त्रिम्रानयानं प्वासम्बमा इद्दियिस्वापि[...]वारिजः॥ स्त्र
वर्यांमूलंपानंच सम्पातं॥ इर्वलानां प्रदातव्या मांसहेमसर रासनम॥ यवनतोयूतंदभ्रवाहान
घ्यकालहितो द्दस्रावाजिनां हितकां क्षितिः॥ ग्रीष्मापाघणं। ०॥ दमेदस्नवघासानां मा[...]

दीप्तं नयाम्लामयान्सेवनान्मिसियारिकीर्तिताः ॥ अदकं दायये द्याः संश्री मूसरदिवाड्गिनां ॥ कालेन्य स्मिंहिती इक्षयक्षो रोग विवर्जितः ॥ सर्वेषू
कालिश्रुघस्त्रु यि । रूवौन्निरत हिता इक्षा वाजी पू क्षिविवद्ध नी ॥ मात्रा वस्निप्र यूडीत ब्रह्मस्थाना सार्वकालिकी ॥ तैलिः कालान्सया ॥ त्रि यं व घद्दिव सोत
२८ कर्मिं ह्रक्ले विड स्नि सं लाननेः ॥ हरिद्राद्द युयिं डीक नागो सिक्त कृाद राकेः ॥ गासूत्र यी षितिः यिं ड प्रात स्वाय ॥ दाप यस् ॥ मंदाग्नि दीपने श्रे ष्ठ पलमक
विरत्तृणः ॥ श्रघवाम्रूरयासाद्धं प्रतिपान्नि नियो जि त ॥ कायाग्निदीपयस्याशू यिंडा यम्पू सिना षितः ॥ ब्रह्मयोषण विक्रमायनः ० ॥ एकस्यवा [illegible] यावीयिम
मष्ठानां तापिववारंता यामार्गश्च स्कापां नसूसं टस्य शुद्धिमासु ॥ गोमूत्रया लिंतक्व वा नाम्रपात्रे निमयाय ॥ मव स्निनातानां मूत्रं न स्य त्व दर्वि पघ्न ॥

ह्नि षणानि छियेत स्मिंरवी लेपत्व मागतो ॥ हिंगूदंसय वक्षारस्यं विवलवनानिच ॥ क्षिप्रेतानिय स्वतावध्यावलेपत्व मागतं ॥ तं ष्र्लिनिनाः श्वां रुक्षा यये छीत
लीटके ॥ वातात्क्रयरात्कक्षिश्रृंदमोसकीलके लोमान्कनस्यदातच्यः क्षार एषसलाकया ॥ क्षार दाह विधानं ॥ ० ॥ वायो प्रक्रयितेत्य धर्मं स्निंदयान्द्विव
दशः ॥ यथा साम्नं निवक्रपा स्निलो हकौर्म दस्रापि वासलाका निघ्वयरा लिप्त तप्ते लोह न्को र्निन ॥ वशर्निविंदु दाह न मेदसा सम दाह तः ॥ अथ वाय्ये
दास्रलोद्दुः पक्वाकाय्युरामरदसा ॥ एवं यः शास्त्रतं सम्यकस्य सिद्धिर्न हरनार दह ॥ प्रथ धालोम वर्मत्सिदद्धितीयया ॥ मांस ह तीय या [illegible]
कलोकयो ॥ श्मया दहदिधानं ॥ ० ॥ गधलाक्षामद द्धिक्षसर्जश्रीयिक्षकिसमिनः मनसिला गुडायातेव निर्मक्षो गुल ायंता ॥ टा वा द्धं गुल

सूकरादिवसान्वितं ध्वतस्मृतेन संवेष्ट्य कर्पटेन विनि क्षिपेत् ॥ श्रूयते नागेन्द्रदेवि ब्राह्मणस्य सिरे वेणुदण्डको । पादस्थाश्च दक्षिणेन श्वेतागे विचक्षण
न्नैदंडस्य छिद्रस्य विचक्षणः । यस्मिन् स्थाने स्थिता वन्नि तन्नैदण्ड विवेशयेत् ॥ श्रावणा गेप्रतीकेण तन्द्रणा नागुलाष्टमं । तस्मिन् दत्वा ततावद्भिः न्य
२५ पिण्डं वंश तदग्रं गोगत ताडं दण्डं विद्वान् परिक्षयेत् ॥ तावद्भिः तायेन वार्त्तां स्थितां नराग तेः ॥ विंश तिदीर्घ येदस्य सवर्द्धयाति तं स्थितो । पत्राकाय समस्तु
...नवं विमच्याति । विश्वमथ सवर्लं उपकृतालं । निर्तत घासम्प्य श्व विज्ञानी याद्विपरीत विपर्ययायेत् ॥ मेदोदाहरु विमानं । ० । श्रद्दं युलंडु विस्मील्लं कर्यो
...नास्ना ब्रीडिम खंमध्यकृत घावालल पत्रकं ॥ अथ मूलं हृद्विपत्रं चन्द्राकारं पकीर्त्तितं । यत्र सोघादिषु प्राकृयातनं तनकाश येत् ॥ सन्त्रेणाल

ब्रीहिवत्रकोलत्वात्तियरू । सिरावेववि विंसमध्यन्दस्य कर्मा प्रघोऽयेत् ॥ खारा भिमस्त्राथाय । ० ॥ अतः परं प्रवक्ष्यामि सिरावेव विनिस्ययं प्रश्नं वाजिनामेत द्विपंऽ
गदितं द्यु खिंशः सिरस्काले निदापाद विकाले वर्षाय सिरां । अर्द्धविनत्ववर्षो पूर्म्मि । तमर्थदिन तथा ॥ सिसिरत्ववसन्तवाष्पदं देवा विचक्षणः ॥ सीतकालसम
मिकालेसिरावेधं प्रयाऽयेत् ॥ सर्व्वेवापरानिलं यद्ब नद्रक्तं वातिकं स्मृतं । श्याश्वानि लकं वायिकृये यि त्रेन दूषितां । माद्धं सपिच्छिनं यांशम् स्मिकं परिकीर्त्तितं ।
द्विरूयेद्धं दसन्नुतस्मकी लंसविया नऊ । ससमालित संकासंयव्रसिंदूरसन्निनं । नद्विसदं नाव दं सिरावेदविनिर्गतं । मरावसकलं स्रावसमं वेदमरवे श्वदः

5

0

centimeter 5 10 15 20 25 30

३०

कयदेन हस्तं दंवद्धारूविरं सन्निवारयेत्॥ अतिवेगाश्र द्धन्नं उयदवं नेवति ष्वनि॥ सिरामूर्ध्वं मतः पाल्लो मामञ्च स्लिंनलेपयेत्॥ मद्दावेगेयदा रक्तमनेनाथि नतिष्ठति

नतः मश्रमरवे प्राह्लोद हलोहमलाकषा॥ वामवाहु क्षिलावाधि तमासवाङ्गुलानरा॥ अग्रग्रवामित्रयं लक्षावृवं थानालकं सिरां संस्वजा स्वविश्राथाश्रयाणाश

लाद्दरे॥ नासिकायाग्रे वस्त्रा घाङ्गुले प्रोषजा सिरा। उर्द्धं उद्धागुले वा पिवा हुमवृत्ति वद्धाणः॥ श्रावर्णोदवरतागेन घाविचरूरंगुलो यीवामनछिया हूंर उउरो निष्का

वाक्रिनः॥ अरमीव व यादिदयः सिरा संलक्ष्य ततस्ततः। किलजां वनरविंध्या त्या त्रिकीमपलरूयेत्॥ क्षिणा वंद्धांगुले तां तत्र्यंगुले वा पि विवायेत्॥ ऊर्द्धं लवा द्वि ज्रटा।

लाला दी विवये सिरा॥ ह्रवजा द्वि वे वह्यो ऊले ह्रव सवि तः॥ द्वंगुले कर्णमूलं ह कर्णजां तानयं निक्ष्य॥ वद्धा घावि दमम्या ह्यीग्रध गता सिरा ऊर्द्धं कर्णास व

वंद्याह्य पिका त्वेउरं उले॥ अंगुलि वधूमा लिङ्क ष्व वं मा विवजाह नः॥ स्वद गुले मस्वाहू ईर्द्धं वजा विवाय सिरा॥ रामया स्विवाद वस्यारधी गुलस्वरसवि तः॥ म

ध्वारंदस्मा धतल जा दिवायद्वं वं॥ कद जानिवाव वधाकक्षा तवरंगुले॥ वामदक्षिणनागेस्नानि नायक्षां गुलान्तरा॥ कोष्ठजा नाडा यरानेघ्रसिरा मास्विरा

धविमा ताह क्ष घ्रा मा मनावंस्थ स्थ से ह्य रलेवस्या सून्तः॥ वर्द्धी वकर्कं पत्रं सिरा विश्रावयद्वं वं॥ ऊरुत्सम्ब रवस्मारविय ह्मि वउरगुलो ऊर्ध्व कोप्यन रद्दिवा

ऊर्ध्वा डा विवाय सिंरा मर्दो स विर वा स्वि व छ्हो रकी त घ इगला छे यले यष्टमूलाव ष्ठ क्षो ताडय सिरा॥ पञ्चा क्षाय सम क्ताने सिराणां जानवी रवगतलां ता।

नोवक्तव्यं प्राङ्मुखं कृत्वेवं तासर्वेषां सोन्नितत्रष्ठेंगाल येष्वात्र कोविदैः श्याय सलावदेषणवर्द्ध सिवा ल्यमेव वा॥ वामांगुष्ठेन संपीड्य सिरां सम्यक्प्रेण ताडयेत्॥ घ्रात॥
तेऽप्रयपृष्ठ वाल विवन विवेष्टयेत्॥ पादास लोमस सनि स्यं लोमा यस्थाप्य विवायेत्॥ प्रमाणं वर्धयाश्येण रक्तं दृष्ट्वा तं शुद्धिमाहुः॥ तालसंरवहरुश्वो घललाटस्थवक
३२ र्लगाःऽत्रावायवसमं सत्रं सिरा विध्यावध्याहुवंःउरा ज्ञाया त्रिकी विवत्त्वरो मात्रं तं घा॥ ग्रंथ्योगलेन साम्रण तलज्ञां बायितात्यत्॥ उयाघ्री क्षोरकी विवद
रुाका घ्रोगवां न घा पूर्वा तो निवसस्त्रिण पृष्ठ ज्ञाम यिवेवयेत्॥ अग्रले प्रक्षिय ष्ठ श्रेष्ठ वष्ठ ज्ञायो तावेवत्॥ वहज्ञायाक्षम न्धी यां द्विवकाले विचरणः॥ सूत्र कोण
वस विद्ध्यम वष्ठ मसत्रस्य वृद्धिमान्॥ यथाप्रमाणं मध्ये यततो निश्रावयेत्सिरां॥ सिराव्यवमथ्यायः ० ॥ अथातोऽवासनविधिं तात्विवक्षायणस्य चाप्रवक्ष्यामिय

यथायोगं मात्रं दृष्ट्वेन कर्मणा॥ कार्षेदंडे रयो निर्वासं गवंसन लाश्चितिः द्वादसांगल दीर्घं दुयरिणाहेषडंगुलं॥ कोणाश्चिश्चिद्रमाणं तु कर्यो नेत्रं विस्तृणः॥
मूलादर्धक मद्धदू नमनं रविशेषनः॥ स्वक्वाग्स्तानि चत्वारि कर्णिका तस्याकारयेत्॥ पृष्ठकस्य प्रवेशायमूलाद्वित्वायि कर्णिको॥ अनेनाछ्छायनेन कुर्याद्दत्वाम
नेमिवच्च॥ यथायोगं त्रिपत्र पारुसर्व रोगोपमा॥ नेये॥ त्रिरात्रं यवरात्रं वासप्तरात्रं मघापयित्वा॥ तो ज्ञयित्वा रुयप्राग्तरसकम्भेरुत्तो ज्ञ नेः॥ ताज्ञिनंतो ज्ञ
ताकानि दिवसान्युखासितां॥ निरुह्यरदृहारम॥ यतरुह निर्यडितः॥ त्रिनिर्वारिः प्रदातथ्यो निरुहसाश्रसालिनि॥ इषतीक्ष्ण पायाकाथय घमः पूष्टाका
शाखेः॥ द्वितीयस्तृतीयश्चतिक्तो विवर्णकोर्णितो॥ एव माष्ठायितवा द्रविनिश्चन्ति निरुहणो॥ कोरस्थ पूष्टकं पश्चास्कंदद्याद्विवर्द्धणः॥ ततोविश्राम यद्ददाम्रा

श्लोकवारं सुगमं। विशोतं स्त्रुमाम्नायां नागे यत्वाय येन्नतः श्लेष्मा स्रवासनं तस्य विकालेव प्रदद्ययये रु॥ श्लोका दूर्वा ङ्कु मञ्जीयत सिंशा त्रोहिता स्रुता॥ यहंवा यिरि
तं दूर्स नागे मा स्रवा सुना॥ यघा कालेत घा था विं नोऊ नं स प्रदाय यायेरु॥ एव रोगा प्रशाम्यन्ति वाजिनां द रुस स्रवाः। पञ्चमूल द्वयं या गंदती चिव सताव री॥ श्वनः
३२ नौ रुहू श्यामा वलाह्विवयनन वा। गरुह्वी तक्रु राक्षि वांक्षरो घ्रिरं ड्वा मकौ॥ यवं रुल कुवदार तघार ग्वव शिग्रुको॥ एतान्या दाय सर्वा णि प्रघाल ब्रा निवा यु नः॥ श्रु
लानि स लिले स्थि ग्नाकघ घित्वा विर च्चूर्णः॥ पादसे घकषायेन निरुहं सं प्रदाय यायरु॥ द्वियं च मूलीन्न सा श्या सा प्रक्षनं निरुहा न। कषायेर सकं चेव ग्गा स्त्रवं कर
शिकं तघा। कल्कं चैव प्रदात थ्यात्तघ जैवं स्थु मानन्तिः ॥ दयरुलामञ्चकं राश्नामदं गोरमर्षयारु॥ एलीत्यकदं कंश्चसतग्रस्थ हरेणुके॥ दूरि द्वादृंसमं शिक्षित।

तघा लवनं पंचकं॥ यघापा दें स मत्रे वा द्र र्न मे लं प्रदा यये रु॥ कपरोल्वणे घ्ना रोगे घृत घ्ना वा तोल्व णे श्च वा॥ निरुहः सं प्रदातव्य श्लेष्म रं गश्च वियुक्षिता। कषायेक ल्कमा
लोद्य निरुहं सं प्रदाय याये रु॥ नचाल्प तं च रुवी मां नेवा ल्पं तं प्य नेत घा॥ यिन्न निरुह कर्न्य श्लीरेण द्वार सेन वा॥ सिंधुमधिम मा युक्तः सर्वरोगप्रशमतः॥ वरर्वा
र्घस्य वारुस्य गरुदान्तं प्रवेषये रु॥ वरुरं यलें निषू ग्र पाञ्जो वाजिमा श्च विसा रद॥ अश्व लत्रंयं त्रिवार्षं द्वि क्षिव सरऊ मनः॥ पञ्चमा सिकव र्षगा॥ नएकामद र
गू लंज नत्वन॥ उदध्नु स्वध्रामूर्खवा टोत्वीवा दुरुस्य पंनि ताम्घृता स्य कं नरुह्मे नपरी क्षमयक र्षयेश श्च यं कृत परी क्षवा स्या न्वेवा र्वा सनं॥ निरुहस्व प्रदातव्यः प
कुनी त्वा य दक्षि णं॥ रदरुग्ना परकपर श्वास यरुणीक क्षता शिणां॥ विशान्न मरुना श्रियक्ष दुरदुग्वा सिनां॥ कृदृसा श्रुमयकानां म यं यीत वता मयिाव डिगोवा

centimeter 5 10 15 20 25 30

२३ ज्ञिनावस्त्रियस्या फलश्री निवीतितः ॥ निरूढ्यासमा ध्यायः ० ॥ ऊर्द्धवक्त्रस्य दोषोस्मित घ्राणवासेम रवस्य चातस्मान्नस्य रंगस्यास मम न्नैं प्रदायये ॥ श्रेग
ख्यकिनसपी ग एकेनासापुटद्वयं ॥ दध्याद्विती येनस्यं रूलपूट स्रष्टमात्रया ॥ नाड्याः स्मकृ धा विधेयधानोद्विग मेरुयस्य प्रगृह्याणाय तशिप्रना
डीयाचाल्पसुदारुणा ॥ तीव्रौषधेयन्नयाना प्यादयुं नस्यविज्ञानता ॥ शीतयूकेनता ॥ येनसीतलेनविसर्पतः ॥ समकालोचिताकार्यो ऽनुपानादिसूविधि
गक्रिया सर्वा समासेन वाक्षिनां हितमिच्छता ॥ वात स्निग्धकास्वाक्षुव पित्तविस्रा इमीतलाकापरंशं वनीहं वनस्य प्राकोन याव नेः ॥ रुद्र पूर्वे न घाते लिः घ
यिघावसयाविवा ॥ स्निग्ध मेस्रुतनस्यं वात्त्वावि प्रसस्यता ॥ ओवनोयिः सम प्राके ःमर्करादौ रवा रिला ॥ श्वादसीतं न वेनस्यं पित्त रूद्धोपनासनावानी

कथ्योषकल्केन निर्गुण्डीस्वरसेन वा ॥ स्नेहं तीक्ष्णसंगोमूत्रं नस्यं श्रोकं कपरां यः ॥ सन्निपातेप्रयोक्तव्यं स्निग्ध शीतल तीक्ष्णकं ॥ द्विरूपेद्विविधं कार्यं नस्यं मतिमता
दारेः ॥ ० ॥ नस्यविज्ञानाध्यायः ॥ ० ॥ यकृत्ताख्यनयो ःश्वेदांतं गास्वेदः सकीर्तितः ॥ वालकायूटाकेस्नाम्ने ःपूट स्वेद दग्धा हृतः ॥ सर्वता महिषासानागोमये
न कुत्रुयवं ॥ अपाय्या कोवह्निनमने सकरंः स्वेदउष्ण ता ॥ अतसीतिलमोसिगोधूमेश्च न किर्यवि ॥ केजिकाखिदनिमानेःपूलाकस्विदउच्याता सता
त्रकोजिकोस्विन्नं उस मसया पुटास्विषशारस स्वेदरूं गायका न्येर्वा पिप्रदापयेत् ॥ कायरुद्ध प्रसंसेतिस्वेद सान्द्रविदोजनाः रूघ्या वाते तिलेन सर्वि
षावाप्रदापयेत् ॥ पित्तरोगाहर श्वानेः रुकात्रे ॥ पियोपासितः ॥ श्वयकीर्तितो वाग्निप्रस्वाया वापि शत्रितनी ॥ स्वेदाध्यायः ० ॥ ह्निरूपाद्या द्विवि

तः पिडस्वाछ स्ववाडिनां। पिलानोऽनसंय स्वयानेदया ञ्छउच्यते। सरक्काले प्रक्षनस्य प्रयोग सर्पियोमतः॥ हेमन्ते सिसिरे विवातिलस्यस [illegible] यलप

विक दारस्यत्रीणि त्रीणि विवर्द्धयेत्॥ पूर्व्वं प्रच्छोनवे ग्रावदक्ठयानेयव स्विविंग॥ अच्छयानाच्वदान थमर्द्ध स्निग्धस्य यडितेः प्रमातवाडिनां दयाङ [illegible] स्रवा

१४ यादिभिः सह॥ एकेनाह्नसन्तं प्रच्छाहूर्द्ध्वं पुनः प्र विंशः ॥ स्याद्काद्व यरो नेव प्रयोग तस्यस स्याता। त्रिरात्रं पंच रात्रं वा मा प्रराश्च मधायिवा दशाहं स्याद

साहंवा दय स्निहानिरन्तरं। वाम्ब्या तायव सदूवीत। स्निद्ग्धा विवक्षणः॥ स्रवोस्नेह सलिलां वेवग्रसन्नं परिकीर्त्तितं॥ स्निग्धाता सर्व्वगात्राणां वर्व्व स्निग्धस

मरु नां सम्यक् स्निग्धस्य वाहस्य डछाह स्निग्धनायात। मरुविंदीनतां विवयदा नाच्वायथ्वतथा। अतिनिर्न्नपूरी वेवस्नतिस्निग्धस्य निर्दिसंस॥ अस्निग्धस्यत

स्यसद ह्यो रुक्षवर्ण्णित मेव वा तास्येव जिघ क्राहृः स्वनस्न ह्युदायये॥ सम्यक् स्निग्धप्रमंसं ति स्निन्ग्यः सान्द्रको विदाः॥ अतिस्निग्धस्य रुक्षस्यवेता निंदितासु

स्निग्धस्य वाह [illegible] क्रायीस्येव विरुक्षणं। नोऽनिः प्रतियान निश्चवक्रमाल्ये रनांतरां॥ स्वरालस्वन संयतं प्रादंतदाद्या स्विवक्षणः॥ यवागूलाजनावेव विवि [illegible]

ता॥ सक्तुग्रसोऽयदस्वतक्रोण्णं स्नानमर्द्दिताः॥ एतच्चो दूष कार्नूपंयवाद्हंवा निसद्भ्वरेः॥ एवं विरुक्षितानां स्नेहस्रपासेकवर्न्निनां॥ कायान [illegible]

डिनां। दले कारेण संयुक्तो याहक्कालेप्र दायाय॥ क्षीर यक्तसरस्वालाद्दमांतमरया वृन्तां सिसिरे लवन्ते धृक्त वमर्ने [illegible] वितां तारिण [illegible]

प्रमस्यात्ताम्रयकवेवदातथं यानेश्वस्नेश्ववाञिषु ॥ समी दादोषयकंवातेलंदद्याद्विवशरणः ॥ अश्रमेदत्तैरदे तैलंमनिश्रं द्वायजायनेतस्माद्द्याद्विस
यावितामेद्काद्यानलेवाहोश्रूलेचातिशाघतघा ॥ स्नेह पानंनरातथ्थायामनवाघाजितेश्रेहयानाथायः ० ॥ मधुकासेरेयस्याकु
३१ मत्रिकोलोरुमं जिषामदन्तेः समेः कोल्लीयातेःयवते लंगाञ्जीरएविवशरणः ॥ पित्तादोषविनासायमधुकाद्यातिमनकं । सुयितैलवमोविव
शरणप्रदसंत कयाघनतकल्किनपावड्डिषघ ॥ त्रि धत्रास्वमहानेलंनस्थयानादिकर्मिकं । वातथाविविनासायकीर्तितयत्नायावतेः । सतेस

लक्षारसेनेवसमनागंधयीसाधयेत् ॥ सिला मालेयपसंसोष्यतंकल्कंवद्धिंतिशूवः ॥ अग्नोतांउनसमेदद्यात्सिन्नउनयनामयोंउ्कवगनसोलाना
नदाबृदस्यचापृथ्यान्धरद्दुसर्वसोयघाप्रा सानिवाप्तनः ॥ परसानिवासमाहुसकंकैटालाविवशरणः ॥ तोउयेदमृतमधकेन्दृवाद्वावउायश
दयतिपदहक्षिमांसेपयेतवर्तिनेःपावरा स्याहतविद्यानवरोगंकपरासकं । शितानिपासउरगंततानेत्रप्रसारयेदाऊनतकमोलिसस्निघा स्त्रि
सिनाकिवर्मणो । ततःश्रीहेमसम्रेणक्कि याश्रद्धावारकंशूवः ॥ तास्कासपयघापीउआयातनोमनागविसहंतमूरायनेत्रंमधूना

ञ्जूथवततसँखऊँवेवयेस्मिरं।ऋष्ठिनववं
॥गरत्नरंञ्नदातथोमूवरंचविसवतःग्र
स्तःयियिथलीविवलोवँचतधाकदकसादि
रेवोस्रेएंसवयवाजिलोचनांकदतिलंक।
पलं।म

घाचाधितघागकदवेनवञतियानँप्रयातथासरयालेवानिःसहः॥निवातंविहितंस्का॥
वारकविकिस्मा। ० ॥घ्रघ्मानिस्यदिनोथस्वस्यस्तनेसाञ्चवलोचनं।कोसंसऊायातनस्थप॥
एंगी।हपरलांयिकुमर्दनुयावामूत्वेणसावयिर॥तनयाद्वसोघनर्कोरुपक्रनेनबुद्धिमाद॥गालि।
षाघनयावितंवाभूनिवदृविडंगकल्कसंयूक्तेनस्थार्धेचप्रकीर्त्तितं।गोरिकर्म्मङवेरंचञ्जननेरहनी 27
रीवंधियथलीविवदिदंसेवववघा।पतानिसमत्तागानिसृष्छसूल्लीनिकायरासे ७

मा॥पतयानँवदातथमेघांरुपरलयाघृतं॥संतर्यं
तः॥पातनपथ्यमावायिविवरुलः॥विविरषसम।
ठ्ठिपेरु॥तास्तायरिस्रंघेपदूवन्नीयाङासासानि
स्मिमिरंनिसुमेरुयेरु॥तोयञ्ञावस्पवाहस्यघ्रस।
सहस्तावनिर्नेकूंवस्याऊनंयर॥मप्रकत्वाद्यसकु।

लंवऊधीतनेचघ्योस्वदनंतरँ।नियासन्नू।मोतरगइ्ढंवक्षसयंत्रितं।वासनूर्लस्यकल्केनयरिदा।यी।द्विसह
द्विक्षानवसत्रघेणेसदा।ञ्ञपरेस्वस्वोयाप्याविविःसंतर्थ्यालेस्मतःनूलंस्निहेनसंस्नाप्य[illegible]नासनरे।
घृकु॥वद्वपद्मपूनर्नेत्रंमहस्त्रिहनासिवायर॥उसलैंवदनं।विवनघासोवीरवांऊनं।वर्लेतावारूथेघा
नांतस्पवाघनः॥पतदेवांऊनञ्ञवतिमिरेयप्रकीर्त्तितं॥रसाऊनगुडविवमधुकोकोडामिवच
त्वोवामासघित्वापूनःपूनः॥तावयेकपर्दकोङमंसीरनाऊनबुद्धिमाद॥ ७

5
0
centimeter 5 10 15 20 25 30

सरां मंडनन तद्भू योत्ता व यिंत्वा विवद्धा ॥ वर्त्तेंकु वा
श्रयात्रा द्विच शूलः ॥ ताय श्राव प्रभं न्नात्वं न क्वाल्वं ति
४० ग्यावाज्ञी मा लिता दुम्न श्चि वं वा सूना स्त्रा त्वे वा न क्वा
समादिसे श ॥ लोहितं यी न कं ॥ विवहरितं नीलकं तथा
स्त्रान शा स्त्रात न मत्र मा य त्री मश्रका यू कं च यरि ना का

घतास्यकं प्रतद्रीयं प्ररायये श ॥ प्रद्धंन्नेताम्रयात्रेण तद्वीयं क्वापये श्मना ॥ कातस्माकऊो
मिंरतघा ॥ श्रेऊयेन्मतिमा त्विघसी सकस्पमलाकया ॥ वातिकादिरोगविकिसया ॥ ० ॥ श्रवा
स्तामस्त्रमकं विमवति ॥ लोचनं कावसंकासयस्याकस्माय ऊायता ॥ क्वावंपित्ता ॥ रुम्मकं ॥ रामं तस्यां विंवा
॥ पित्ता ... दिनो स्थानत्र माश्रय ऊायात ॥ प्रयोडरीकमश्रकं चंदन लोवामिवस्ता ॥ एकोदरस्य ऊालम्या
यगोपयः ॥ श्रक्क यात सिरावावाहितत्वा पिप्रकीर्त्तितः ॥ लोहितं मश्रकं संखराप्रमस्यलमिवच ॥

स्त्रापय्यताऊ नेत्रा म्रेगवां मूत्रेण ता दये श ॥ वहसो
तिलो हितं ॥ सर्वं मत्रं त्रिम्ता गं वा श्राव स्त्रदा हपीडि
ह्वो श्रश्वस्थान त्र रोग प्रवर्त्त नि ॥ सिरा नेत्रापि
ऊाघ्रक्रा ॥ सा गदाः ॥ ऐदिताली सयत्रंच मंजिष्ठाम
हऊंनततः कघीरया मा ॥ द्विप्तमिदं कुत्वः ॥ विज्ञात

नावयित्वा श्च न स्त्र कूं प्रयीषये श ॥ मूर्त्तंऊनमिदं श्रेष्ठं नेत्ररोगविनासनो ॥ रक्ता ॥ त्रिशं दिनो स्थानत्र तव
तारक्त स्रावो घवा ॥ येन वाऊि नालोचना ह्रावश ॥ रक्तास्रावा त्रिमनं ता नेत्रा ॥ रोगसमादिसे श ॥ श्रत्रिपातो
पाताश्च रक्त सरस्य व श्रु घः ॥ चिकित्सा ॥ वे यो वक्षा मिय त्वो दिष्टं समासतः ॥ ॥ यन सा म्यनिवाहा ॥ नारक्त
श्कं निसा ॥ काला ॥ रस्रा विनी मूर्वा वारिणा सह स्त्रावयेत ॥ त्रिनमी ॥ तन स्त्रद्धेन नेत्र मा श्वात ये
वयालं रोऊंका स्मयीं त्रय पारलं तत्र घा ॥ मध्व कां सर्करा ॥ विवन त्वा ॥ विवरसा ऊनं ॥ पता निसमन

एसदृयोगश्चेह ॥ हन्यादाढ्यं च रक्तं च वर्त्तिरेखाञ्जला श्चिता । मंजिष्ठा हरितालं च लोध्रं वालकमेव च ॥ हरेणुकं तथा कुष्ठं मसीरं च मनःशिलां [illegible]

४२ वेक्षायायायपरिसोषयेत ॥ कल्प द्राक्षिपमश्चसावर्त्ति निन्न कल्कहिता । स्को सिद्धार्द्द चिकित्सा ॥ ० ॥ अथ क्षाद्यपरिक्षा क्षयरक्तं यस्य ज्ञायाता । रूपाण्छिन्न यत्र [illegible]

वित क्षामेएवा ॥ हरीतं नीलकं पित्ताद्दाता लोहित कंनवेग ॥ दृश्यते पानं मल्के पक्लोश्म सलवं । संकोल्लिव लिविरूढ्यं सन्निपात समरूवं । असाध्यन्त द्धि [illegible]

याञ्छुमाद्धमद्यापिवा ॥ हंसं वरकाऊं विंद्याक्ष्टल साश्रको विदः । अतः ऊर्द्ध प्रवक्ष्यामि यद्यायोगं चिकित्सितं । पलेरलेखु व सार्ल्लसि गवेतप्प ससाता । शुम

पात्रपया । एचललाट त्रिवसरक्व योः । स्रे क्षाउस्य द्दितहृह्नमऊनमवास ववायरलस्यगवास्रग्राक्षोर य कंचालन्दवागोर्द नासन्नवंचिवदृहिनाल मनद्दि

धर्मरत्न बज्राचार्य गुरत श्री महाबिहार II-362